CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
S.D.P.B.
Coll. No. 52

Title BATUKA BHAIRAVA KAVACA.

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 52 Subject: Tantric Ritual

Title: Batuka Bhairava Kavaca.

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: Place of the Ms.: —

Size: 8·1" by 4·5" Extent: 1 foll.

Language: Sanskrit. Script: Devanagari.

Remarks: [illegible]

॥श्रीगणेशाय नमः॥ ॥श्रीदेव्युवाच॥ ॥कथयामि महाप्राज्ञ क-
वचं बटुकस्य च॥ गोपनीयं प्रयत्नेन मातृजारोपमो यथा॥१॥ ॐ
अस्य श्रीमहाराजाधिराज बटुकभैरवकवचस्य आनंद-
भैरव ऋषि अनुष्टुप् छंदः॥ आपदुद्धारबटुकभैरवो देवता
ह्रीं बीजं स्वाहा शक्तिः ओं ह्रीं कीलकं मम सकलपापक्षयार्थे
जपे विनियोगः॥ ॥सहस्रारमहापद्मे कर्पूरधवलो गुरुः
पातु मां बटुको देवो भैरवः सर्वकर्मसु॥१॥ पूर्वस्यामसि-
तांगो मे दिशि रक्षतु सर्वदा। आग्नेयां च रुरुः पातु दक्षिणे
चंड भैरवः॥२॥ नैरृत्यां क्रोधनः पातु मामुन्मत्तश्च पश्चिमे
वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः॥३॥